DPN 5708

Title : संक्षेप प्रदोष पूजा विधि SAṂCHEPA PRADOṢA PŪJĀ VIDHĪ

Run. No. 6399 Cat. No. Micro. No.

Subject विधि / Ritual Religion : Hindu / Bauddha

Language : Skt.✓ / New. / Nep. / Skt. - New. / Maith. - New. / New. - Nep. /

Size in cms. 22 × 10 Folios 3 Lines (in a page) 11

Compl.✓ / Incompl. Chapt. / act /

Author✓ / translator द्विजवेदशर्मा Scribe / donor

Date: NS / SS / VS / KS शाके 1748 Ruler / place

Script : New. / Dev.✓ / Bhuj. / Ran. / Illus. :

Material : palmleaf / paper✓ / thyasaphu /

Condition : fine✓ / damaged by worms, rats, water /

Beginning, colophon, post-colophon :

श्री गणेशाय नमः ॥ अथ प्रदोष पूजा ॥ ततः घटिका द्वय दिनावशेषे सुस्नातः सुलिप्त स्थानोपाविश्य मौनी भूत्वा नित्य कर्मादिकं विधाय ... अद्य अमुक गोत्रस्यामुक शर्म्मणो मम सकलारिष्ट

क्षम बल पौष्टिक कामाय श्रुति स्मृति पुराणोक्त फलावाप्त्ये आजन्मोपार्जित पाप क्षयार्थे
विशेषत: सकल सौभाग्य फल पुत्रादि फल प्राप्त्यर्थं दारिद्र्य भंजनार्थं सां वाछित
पार्थिव पूजा सामग्रीमकिंचिंत्य दीपं संपूज्य दीपनाथाय नमः ॥

समाप्ति / colophon post- colophon

इति हिक्षेप प्रदोष पूजा विधि: समाप्त: ॥शाके १७८६ मिति आश्विन वदि १२ रोज १
लिखितं वेदशर्मा द्विजेन ॥

॥ दोकापूजाको विधिः १

प्र·पू· श्रीगणेशायनमः॥ ॥अथप्रदोषपूजा॥ ॥ततःघटिकाद्वयदिनावशेषेसुस्नातःसुलिप्त
१ स्थानेोपविश्यमौनीभूत्वानित्यकर्म्मादीन्विधाय·विभूतिंरुद्राक्षमालांत्वधृत्वापूजामार
भेत॥अद्यअमुकगोत्रस्यामुकशर्मणोममसकलारिष्टक्षयबलपोष्टिककामायश्रुतिस्मृ
तिपुराणोक्तफलावाप्तयेआजन्मोपार्जितपापक्षयार्थेविशेषतःसकलसौभाग्यफलप्राप्त्यादि
फलप्राप्त्यर्थंदारिद्र्यभंजनार्थंसांवशिवपार्थिवपूजनमहंकरिष्ये।इतिसंकल्प्य·ततश्चतुष्को
णंत्रिकोणंविलिख्य।गंगेचयमुनेइति॥अंकुशेनमुद्रयासकलतीर्थान्यावाह्यमूलमंत्रं
दशवारंजप्त्वाकिंचिज्जलंस्वशिरसिसंसिच्यपूजासामग्रीमभिषिंच्यदीपंसंपूज्यदीपना
रायणायनमः॥वंवरुणायनमः।इतिकलशंसंपूज्य·गंगणपतयेनमः।आंआधारश
क्त्यादिभ्योनमः।अपसर्प्पन्तुयेभूतायेभूताभूमिसंस्थिताः।येभूताविघ्नकर्तारस्तेनश्यं
तुशिवाज्ञया॥इतिविघ्नानुत्सार्य।मूलेमंत्रेणप्राणायामत्रयंकृत्वापार्थिवंस्थाप्य।ओंह्रीं राम:
क्रोंभूलपाशे·जीवःप्राणाःसर्वेन्द्रियाणिचइहागच्छंतुइहतिष्ठंतुस्वाहा॥देवेत्रभक्ति

सुलभपरिवारसमन्वित॥यावत्त्वांपूजयिष्यामितावत्त्वंसुस्थिरोभव।सांगायसावरणाय०
सायुधाय०सवाहनाय०सपरिवारउताय०सांवशिवाय०पाद्यंसमर्पयामिनमः।एवंअर्घं
स्नानंपंचामृतम्·शुद्धगंगोदकं०पुनराचमनम्०वस्त्रं०यज्ञोपवीतं·सुगंधाक्षतपुष्पा
णिबिल्वपत्रं।माहेश्वर्यसिंदूरमपि॥धूपं।वनस्पतीति।दीपम्।त्वंज्योतिरितिमंत्रेण·
नैवेद्यं।आभूषणं·तांबूलम्·पूगीफलम्।सुगंधिद्रव्यं।आदर्शनं।चामरंसमर्पया
मिनमः।सकलपीठदेवेभ्योनमः।सकलावरणदेवेभ्योनमः॥सकलायुधेभ्योनमः।स
कलवाहनेभ्योनमः।स्वपरिवारेभ्योनमः।नवशक्तिभ्योनमः।सकलगुरुपंक्तिभ्योनमः।स्कं
दादिसकलकुमारेभ्योनमः।नंद्यादिसकलगणेभ्योनमः।सकलदेवेभ्योनमः।वामावर्तेन
शर्वायक्षितिमूर्तयेनमः।भवायजलमूर्तयेनमः।रुद्रायतेजमूर्तयेनमः॥उग्राय
वायुमूर्तयेनमः।भीमायआकाशमूर्तयेनमः।पशुपतयेयजमानमूर्तयेनमः।
महादेवायसोममूर्तयेनमः।ईशानायसूर्यमूर्तयेनमः।नीराजनम्॥ओंकास

प्र॰पू॰
२

श्रीशैवषडाक्षरमंत्रस्य॰ वामदेव ऋषिः पंक्तिश्छंदः श्रीसदाशिवो देवता॰ ॐ बीजं॰ नमः शक्तिः
शिवाय कीलकं मम श्रीसदाशिवप्रीत्यर्थे जपे विनियोगः। इति करसंपुटेन स्मृत्वा। ॐ वाम
देवाय ऋषये नमः। शिरसि। ॐ पंक्तौछंदसे नमो मुखे॰ श्रीसदाशिवो देवतायै नमो हृदि॰
ॐ बीजाय नमो गुह्ये॰ ॐ नमः शक्तये नमः पादयोः। ॐ शिवाय कीलकाय नमः नाभौ॰
मम श्रीसदाशिवप्रीत्यर्थे जपे विनियोगः। नमः सर्वांगे। इति ऋष्यादिन्यासः। ॐ अंगुष्ठा
भ्यां नमः। ॐ तर्जनीभ्यां नमः। मं मध्यमाभ्यां नमः। शिं अनामिकाभ्यां नमः। वां कनिष्ठिका
भ्यां नमः। यं करतलकरपृष्ठाभ्यां नमः। इति करन्यासः। अथ षडंगन्यासः। ॐ हृदया ॐ
य नमः। नं शिरसे स्वाहा। मं शिखायै वषट्। शिं कवचाय हुम्। वां नेत्रत्रयाय वौषट्। यं
अस्त्राय फट्। ततो षडंगयुवतीयुक्तन्यासः। ॐ सर्वज्ञशक्तिनाम्ने नेत्रत्रयाय वौषट्।
ॐ मं अनादिबोधशक्तिधाम्ने कवचाय हुं। ॐ वां अलुप्तशक्ति[illegible]। ॐ यं अनंतशक्ति
शक्तिधाम्ने अस्त्राय फट्। इति षडंगयुवतीन्यासः। ततो ध्यानम्। ध्यायेन्नित्यं महेशं रजतगिरिनिभं चारुचंद्रावतंसं रत्नाकल्पोज्ज्वलांगं परशुमृगवराभीतिहस्तं प्रसं २

४× हृदयाय नमः। ॐ नं नित्यतृप्तिशक्तिधाम्ने कवचाय हुं। ॐ वां अ

प्र॰पू॰
३
कर्मजं ४

न्नम्॥ पद्मासीनं समंतात् स्तुतममरगणैर्व्याघ्रकृत्तिं वसानं विश्वाद्यं विश्ववंद्यं निखि
लभयहरं पंचवक्त्रं त्रिनेत्रम्॥ यो योगमायापहृतेन पुंसां ज्ञानं विधत्ते किल कुंठनिष्ठं॥
तं विश्वनाथं किल कल्मषघ्नं ध्यायेच्छिवालिंगितहृष्टदेहम्॥ आवाहनं न जानामि
ति। करचरणकृतं वाक्कायजं कर्मजं वा श्रवणनयनजं वा मानसं वापराधम्॥ विहितम
विहितं वा सर्वमेतत्क्षमस्व जय जय करुणाब्धे श्रीमहादेव शंभो॥ ओंध्व
नि कृत्वा संहारमुद्रया चंडेश्वराय नमः॥ इति पूजां विसृज्य। यत्कृतं तत्सु
कृतमस्तु यन्न कृतं तत् सांबशिवप्रसादात् सर्वं परिपूर्णमस्तु॥ दक्षिणां संकल्पं
कुर्यात्॥ इति संक्षेपप्रदोषपूजाविधिः समाप्तः॥ शाके १७४८ मिति आश्वि रामः
नवदि १२ ऐंज १ लिखितं वेदशर्मद्विजेन॥ गिरिसुतावल्लभाय नमो नमः। ३
विजितमदनदर्पः सर्पराजोपवीतो धवलवृषभगामी यामिनीनाथमूर्द्धा॥ विविधहरितपनाद्यैः
पूजितः पूजनीयैः दिशतु गिरिसुतायावल्लभो वो विभूतिम्॥१॥

0 CMTS. 5 10 15 20 25 30

प्रदीक्षणाको विधिः॥ ॥